४८

११. राजेन्द्र मोक्ष

आशा अभिलेखालय
ASHA ARCHIVES
2969

श्रीगणेशायनमः॥ ॥शुकउवाच॥आसीद्गिरिवरोराजन्त्रिकूटइतिविश्रुतः
क्षीरोदेनावृतःश्रीमान्योजनायुतमुच्छ्रितः॥१॥तावतविस्तृतःपर्यक्त्रिभिः
श्रृंगैःपयोनिधिम्॥दिशःखंरोचयन्नास्तेरौप्यायसहिरण्मयैः॥२॥अन्यैश्च
ककुभःसर्वारत्नधातुविचित्रितैः॥नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झरांभ
सां॥३॥सचावनिज्यमानांघ्रिःसमन्तात्पयऊर्मिभिः॥करोतिश्यामलांभूमिं ॥राम:॥
हरिन्मरकताश्मभिः॥४॥सिद्धचारणगन्धर्वविद्याधरमहोरगैः॥किन्नरैर ॥१॥
प्सरोभिश्चक्रीडद्भिर्जुष्टकंदरः॥५॥यत्रसंगीतसन्नादेनदद्गुहममर्षयाः

अभिगर्जन्तिहरयःश्लाघिनःपरसंकया॥६॥नानारण्यपशुव्रातसंकुलद्रो
ण्यलंकृतः॥चित्रद्रुमसुरोद्यानःकलकंठविहंगमः॥७॥सरित्सरोभिरच्छो
दैःपुलिनैर्मणिवालुकैः॥देवस्त्रीमज्जनामोदसौरभांब्वनिलैर्युतः॥८॥
तस्यद्रोण्यांभगवतोवरुणस्यमहात्मनः॥उद्यानमृतुमंनामआक्रीडंसुर
योषिताम्॥९॥सर्वतोलंकृतंदिव्यैर्नित्यपुष्पफलद्रुमैः॥मंदारैःपारिजा
तैश्चपाटलाशोकचंपकैः॥१०॥चूतैःप्रियालैपनसैराम्रैराम्रातकैरपि॥
क्रमुकैर्नारिकेलैश्चखर्जूरैर्बीजपूरकैः॥११॥मधुकैःशालतालैश्चतमालै

॥ग॰मो॥
॥४॥

रसनार्जुनैः॥ अरिष्टोडुंवरप्लक्षैर्वटैः किंशुकचंदनैः॥१२॥ पिचुमंदैः कोविदा
रैः सरलैः सुरदारुभिः॥ द्राक्षेक्षुरंभाजंबूभिर्वदर्यक्षाभयामलैः॥१३॥ विल्वैः
कपित्थैर्जंबीरैर्वृतोभल्लातकादिभिः॥ तस्मिन्सरः सुविपुलं लसत्कांचनपंकजं
॥१४॥ कुमुदोत्पलकल्हारशतपत्रश्रियोर्जितम्॥ मत्तषट्पदनिर्घुष्टं स
कुंतैश्चकलस्वनैः॥१५॥ हंसकारंडवाकीर्णं चक्राह्वैः सारसैरपि॥ जलकुक्कु ॥सम्व:॥
टकोयष्टिसकुंतैश्चकलस्वनैः॥१६॥ मत्स्यकच्छपसंचारचलत्पद्मरजः ॥२॥
पयः॥ कदंववेतसनलनीपवंजुलकैर्वृतं॥१७॥ कुंदैः कुरवकाशोकैः शि

रीषैः कुटजेंगुदैः॥ कुब्जकैः स्वर्णयूथीभिर्नागपुंनागजातिभिः॥१८॥ मल्लिकाशतपत्रैश्च
माधवीजालकादिभिः॥ शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलंद्रुमैः॥१९॥ तत्रैकदातद्गि
रिकाननाश्रयः करेणुभिर्वारणयूथपश्चरन्॥ सकंटकान्कीचकवेणुवेत्रवद्विशा
लगुल्मंप्ररुजन्वनस्पतीन्॥२०॥ यद्गंधमात्राद्धरयोगजेंद्रा व्याघ्रादयो व्यालमृग
ाः सखड्गाः॥ महोरगाश्चापिभयाद्द्रवंतिसगौरकृष्णाः सरभाश्चमर्यः॥२१॥ वृकाव
राहामहिषर्क्षशल्यागोपुच्छशालावृकमर्कटाश्च॥ अन्यत्रक्षुद्राहरिणाःशशा
दयश्चरंत्यभीतायदनुग्रहेण॥२२॥ सघर्मतप्तःकरिभिःकरेणुभिर्वृतोमदच्युत्कल

वि२

॥ग.मो॥ ॥२॥

भिरनुद्रुतः॥ गिरिंगरिम्णापरितःप्रकंपयन्निषेव्यमाणोलिकुलैर्मदाशनैः॥२३॥ सरो
निलंपंकजरेणुरूषितंजिघ्रन्विदूरान्मदविह्वलेक्षणः॥ वृतःस्वयूथेनतृषार्दितेनतत्
सरोवराभ्यासमथागमद्द्रुतम्॥२४॥ विगाह्यतस्मिन्नमृतांबुनिर्मलंहेमारविंदोत्प
लरेणुवासितम्॥ पपौनिकामंनिजपुष्करोद्धृतमात्मानमद्भिःस्नपयन्गतक्लमः॥
२५॥ सपुष्करेणोद्धृतसीकरांबुभिर्निपाययन्संस्नपयन्यथागृही॥ घृणीकरेणु
ःकलभांश्चदुर्मदोनाचष्टकृच्छ्रंकृपणोजमायया॥२६॥ तंतत्रकश्चिन्नृपदैव ॥राम॥
चोदितोग्राहोबलीयांश्चरणेरुषाग्रहीत्॥ यदृच्छयैवंव्यसनंगतोगजोयथाबलंसो ॥३॥

तिबलोविचक्रमे॥२७॥ तथातुरंयूथपतिंकरेणवोविकृष्यमाणंतरसाबलीयसा॥ वि
चुक्रुशुर्दीनधियोपरेगजाःपार्ष्णिग्रहास्तारयितुंनचाशकन्॥२८॥ नियुध्यतोरेव
मिभेंद्रनक्रयोर्विकर्षतोरंततोबहिर्मिथः॥ समाःसहस्रंव्यगमन्महीपतेसप्राण
योश्चित्रममंसतामराः॥२९॥ ततोगजेंद्रस्यमनोबलोजसांकालेनदीर्घेणमहा
नभूद्व्ययः॥ विकृष्यमाणस्यजलेवसीदतोविपर्ययोभूत्सकलंजलौकसः॥३०
इत्थंगजेंद्रःसयदापसंकटंप्राणस्यदेहीविवशोयदृच्छया॥ अपारयन्नात्मवि
मोक्षणेचिरंदध्याविमांबुद्धिमथाभ्यपद्यत॥३१॥ नमामिमेज्ञातयआतुरंग

५३

॥ग॰मो॰॥ जाःकुतःकरिण्यःप्रभवंतिमोचितुम्॥ग्राहेणपाशेनविधातुरावृतोप्यहंचतंयामिप
॥४॥ रंपरायणम्॥३२॥यःकश्चनेशोबलिनोंतकोरगात्प्रचंडवेगादभिधावतोभृशं॥भी
तंप्रपन्नंपरिपातियद्भयान्मृत्युःप्रधावत्यरणंतमीमहि॥३३॥इतिश्रीभागवतेमहा
पुराणेअष्टमस्कन्धेगजेंद्रोपाख्यानेद्वितीयोध्यायः॥२॥श्रीशुकउवाच॥एवंव्य
वसितोबुद्ध्यासमाधायमनोहृदि॥जजापपरमंजाप्यंप्राग्जन्मन्यनुशिक्षितम्
१॥गजेंद्रउवाच॥ॐनमोभगवतेतस्मैयतएतच्चिदात्मकम्॥पुरुषायादिबीजाय ॥गम॰॥
परेशायाभिधीमहि॥२॥यस्मिन्निदंयतश्चेदंयेनेदंयइदंस्वयम्॥योस्मात्परस ॥५॥

५

माच्चपरस्तंप्रपद्येस्वयंभुवम्॥३॥यःस्वात्मनीदंनिजमाययार्पितंक्वचिद्विभातंक्वच
तत्तिरोहितं॥अविद्धदृक्साक्ष्युभयंतदीक्षतेसआत्ममूलोवतुमांपरात्परः॥४॥काले
नपंचत्वमितेषुकृत्स्नशोलोकेषुपालेषुचसर्वहेतुषु॥तमस्तदासीद्गहनंगभीरंय
स्तस्यपारेभिविराजतेविभुः॥५॥नयस्यदेवाऋषयःपदंविदुर्जंतुःपुनःकोर्हति
गंतुमीरितुम्॥यथानटस्याकृतिभिर्विचेष्टतोदुरत्ययानुक्रमणःसमावतु॥
६॥दिदृक्षवोयस्यपदंसुमंगलंविमुक्तसंगामुनयःसुसाधवः॥चरंत्यलोकव्रतं
मव्रणंवनेभूतात्मभूताःसुहृदःसमेगतिः॥७॥नविद्यतेयस्यचजन्मकर्मवानना

गज्मो॥ ५॥

मरूपेगुणदोषस्ववा॥ तथापिलोकाप्ययसंभवायस्वमाययातान्यनुकालमृच्छती
८॥ तस्मैनमःपरेशायब्राह्मणेनंतशक्तये॥ अरूपायोरुरूपायःनमआश्चर्यकर्मणे
९॥ नमआत्मप्रदीपायसाक्षिणेपरमात्मने॥ नमोगिरांविदूरायमनसश्चेतसाम
पि॥१०॥ सत्वेनप्रतिलभ्यायनैःकर्म्येणविपश्चिता॥ नमःकैवल्यनाथायनिर्वा
णसुखसंपदे॥११॥ नमःशांतायघोरायमूढायगुणधर्मिणे॥ निर्विशेषायसा
म्यायनमोज्ञानघनायच॥१२॥ क्षेत्रज्ञायनमस्तुभ्यंसर्वाध्यक्षायसाक्षिणे॥ पुरु ॥राम॥
षायात्ममूलायमूलप्रकृतयेनमः॥१३॥ सर्वेंद्रियगुणद्रष्टेसर्वप्रत्ययहेतवे॥ ॥५॥

असताछाययोक्तायसदाभासायतेनमः॥१४॥ नमोनमस्तेखिलकारणायनिष्कारणा
याद्भुतकारणाय॥ सर्वागमाम्नायमहार्णवायनमोपवर्गायपरायणाय॥१५॥गु
रा णारणिछन्नचिदूष्मपायतत्क्षोभविस्फूर्जितमानसायः॥ नैष्कर्म्यभावेनविवर्जिताय·
स्वयंप्रकाशायनमस्करोमि॥१६॥ मादृक्प्रपन्नपशुपाशविमोक्षणाय·मुक्तायभू
रिकरुणायनमोलयाय·स्वांशेनसर्वतनुभृन्मनसिप्रतीत·प्रत्यक्दृशेभगवतेबृहते
नमस्ते॥१७॥ आत्मात्मजाप्तगृहवित्तजनेषुशक्तैर्दुःप्रापणायगुणसंगविवर्जि·
ताय॥ मुक्तात्मभिःस्वहृदयेपरिभावितायज्ञानात्मनेभगवतेनमईश्वराय॥१८॥

॥गज्मो॥ यंधर्मकामार्थविमुक्तिकामाभजंतइष्टांगतिमाप्नुवंति॥ किंचाशिषोरात्यपिदेहमव्य
॥६॥ यंकरोतुमेदभ्रदयोविमोक्षणम्॥१९॥एकांतिनोयस्यनकिंचनार्थंवांछंतियेवैभ
गवत्प्रपन्नाः॥अत्यद्भुतंतच्चरितंसुमंगलंगायंतआनंदसमुद्रमग्नाः॥२०॥तमक्ष
रंब्रह्मपरंपरेशमव्यक्तमाध्यात्मिकयोगगम्यं॥अतींद्रियंसूक्ष्ममिवातिदूरमनंत
माद्यंपरिपूर्णमीडे॥२१॥यस्यब्रह्मादयोदेवावेदालोकाश्चराचराः॥नामरूपवि
भेदेनफल्ग्व्याचकलयाकृताः॥२२॥यथार्चिषोग्नेःसवितुर्गभस्तयोनिर्यांतिसं॥राम॥
यांत्यसकृत्स्वरोचिषः॥तथायतोयंगुणसंप्रवाहोःबुद्धिर्मनःखानिसरीरसर्गाः॥२३ ॥६॥

खे॰चि॰

स

सवैनदेवासुरमर्त्यतिर्यङ्नस्त्रीनषंढोनपुमांनजंतुः॥नायंगुणःकर्मनसन्नचासन्निषेध
शेषोजयतादशेषः॥२४॥जिजीविषेनाहमिहामुया॥किमन्तर्बहिश्चावृतयेभयो
न्या॥इच्छामिकालेननयस्यविप्लवस्तस्यात्मलोकावरणस्यमोक्षम्॥२५॥सोहंविश्व
सृजंविश्वमविश्वंविश्ववेदसं॥विश्वात्मानमजंब्रह्मप्रणतोस्मिपरंपदं॥२६॥योगरं
धितकर्माणोहृदियोगविभाविते॥योगिनोयंप्रपश्यंतियोगेशंतंनतोस्म्यहम्॥२७॥
नमोनमस्तुभ्यमसह्यवेगशक्तित्रयायाखिलधीगुणाय॥प्रपन्नपालायदुरंतशक्तये
कदिंद्रियाणामनवाप्यवर्त्मने॥२८॥नायंवेदस्वमात्मानंयच्छक्त्याहंधियाहतं॥तंदुरा

॥ग॰मो॰॥
॥८॥

न्ययमाहात्म्यंभगवंतमितोस्म्यहम् ॥ २९ ॥ श्रीशुकउवाच ॥ एवंगजेंद्रमुपवर्णितनिर्विशेषं
ब्रह्मादयोविविधलिंगभिदाभिमानाः ॥ नैतेयदोपससृपुर्निखिलात्मकत्वात्त-
त्राखिलामरमयोहरिराविरासीत् ॥ ३० ॥ तंतद्वदार्त्तमुपलभ्यजगन्निवासः स्तोत्रंनि
शम्यदिविजैःसहसंस्तुवद्भिः ॥ छन्दोमयेनगरुडेनसमुह्यमानश्चक्रायुधोभ्य
गमदाशुयतोगजेंद्रः ॥ ३१ ॥ सोंतःसरस्युरुबलेनगृहीतआर्त्तोदृष्ट्वागरुत्मतिह
रिंखउपात्तचक्रं ॥ उत्क्षिप्यसांबुजकरंगिरमाहकृच्छ्रान्नारायणाखिलगुरोभ ॥राम॥
गवंनमस्ते ॥ ३२ ॥ तंवीक्ष्यपीडितमजःसहसावतीर्यसग्राहमाशुसरसःकृपयो- ॥८॥

ज्जहारः ॥ ग्राहाद्विपाटितमुखादरिणागजेंद्रंसंपश्यतांहरिरमूमुचदुच्छ्रियाणाम्
३३ ॥ इतिश्रीभा॰गजेंद्रमोक्षणंनामातृतीयोध्यायः ॥ ३ ॥ श्रीशुकउवाच ॥ तदादे
वर्षिगन्धर्वाब्रह्मेशानपुरोगमाः ॥ मुमुचुःकुसुमासारंशंसंतःकर्मतद्धरेः ॥ १ ॥ नेदु
र्दुन्दुभयोदिव्यागन्धर्वाननृतुर्जगुः ॥ ऋषयश्चारणासिद्धास्तुष्टुवुःपुरुषोत्तमं ॥ २
योसौग्राहःसवैसद्यःपरमाश्चर्यरूपधृक ॥ मुक्तोदेवलशापेनहूहूर्गंधर्वसत्तमः
३ ॥ प्रणम्यशिरसाधीशमुत्तमश्लोकमव्ययम् ॥ अगायतयशोधामकीर्त्तन्य-
गुणसत्कथम् ॥ ४ ॥ सोनुकंपितईशेनपरिक्रम्यप्रणम्यतम् ॥ लोकस्यपश्यतो-

॥ग॰मो॰॥
॥८॥

लोकंस्वमगान्मुक्तकिल्बिषः॥५॥गजेंद्रोभगवत्स्पर्शाद्विमुक्तोऽज्ञानबंधनात्॥प्राप्तो
भगवतोरूपंपीतवासाश्चतुर्भुजः॥६॥सवैपूर्वमभूद्राजापांड्योद्रविडसत्तमः॥इंद्र
द्युम्नइतिख्यातोविष्णुव्रतपरायणः॥७॥सएकदाराधनकालआत्मवान्गृहीत
मौनव्रतईश्वरंहरिम्॥जटाधरस्तापसआप्लुतोच्युतंसमर्चयामासकुलाचलाश्र
यः॥८॥यदृच्छयातत्रमहायशामुनिःसमागमच्छिष्यगणैःपरिश्रितः॥तंवीक्ष्य
तूष्णीमकृतार्हणादिकंरहस्युपासीनमृषिश्चुकोपह॥९॥तस्माइमंशापमदादः
साधुरयंदुरात्माकृतबुद्धिरद्य॥विप्रावमंताविशतांतमोंधंयथागजःस्तब्धमतिःस

॥राम॥
॥८॥

एव॥१०॥श्रीशुकउवाच॥एवंशप्त्वागतोगस्त्योभगवान्नृपसानुगः॥इंद्रद्युम्नोपि
राजर्षिर्दिष्टंतदुपधारयन्॥११॥आपन्नःकौंजरींयोनिमात्मस्मृतिविनाशिनीं॥
हर्यर्चनानुभावेनयद्गजत्वेप्यनुस्मृतिः॥१२॥एवंविमोक्ष्यगजयूथपमब्जनाभस्ते
नापिपार्षदगतिंगमितेनयुक्तः॥गंधर्वसिद्धविबुधैरुपगीयमानःकर्माद्भुतंस्वभ
वंगरुडासनोगात्॥एतन्महाराजतवेरितोमयाकृष्णानुभावोगजराजमोक्षणम्
१४॥यथानुकीर्तयंत्येतच्छ्रेयस्कामाद्विजातयः॥शुचयःप्रातरुत्थायदुःस्वप्नाद्यु
पशांतये॥१५॥इदमाहहरिःप्रीतोगजेंद्रंकुरुसत्तमः॥शृण्वतांसर्वभूतानांसर्व

स्वर्ग्यंयशस्यंकलिकल्मषापहंदुःस्वप्ननाशंकुरुवर्यशृण्वतां

॥गजें॥ भूतमयोविभुः॥१६॥श्रीभगवानुवाच॥येमांत्वांचसरश्चेदंगिरिकंदरकाननं॥वे

॥९॥ त्रकीचकवेणूनांगुल्मानिसुरपादपान्॥१७॥शृंगाणीमानिधिष्ण्यानिब्रह्मणो

मेशिवस्यच॥क्षीरोदंमेप्रियंधामश्वेतद्वीपंचभास्वरं॥१८॥श्रीवत्संकौस्तुभंमा

लांगदांकौमोदकींममः॥सुदर्शनंपांचजन्यंसुपर्णंपतगेश्वरम्॥१९॥शेषंच

मत्कलांसूक्ष्मांश्रियंदेवींमदाश्रयाम्॥ब्रह्माणंनारदमृषिंभवंप्रल्हादमेवच॥

२०॥मत्स्यकूर्मवराहाद्यैरवतारैःकृतानिमे॥कर्माण्यनंतपुण्यानिसूर्यंसोमं ॥राम॥

हुताशनं॥२१॥प्रणवंसत्यमव्यक्तंगोविप्रान्धर्ममव्ययम्॥दाक्षायणीर्धर्म ॥९॥

पत्नीःसोमकश्यपयोरपि॥२२॥गंगांसरस्वतींनंदांकालिंदींसितवारणं॥ध्रुवं

ब्रह्मऋषीन्सप्तपुण्यश्लोकांश्चमानवान्॥२३॥उत्थायापररात्रांतेप्रयताःसुसमा

हिताः॥स्मरंतिममरूपाणिमुच्यंतेह्येनसोखिलात्॥२४॥येमांस्तुवंत्यनेनांग

प्रतिबुध्यनिशात्यये॥तेषांप्राणात्ययेचाहंददामिविमलांमतिम्॥२५॥श्रीशु

कउवाच॥इत्यादिश्यहृषीकेशःप्रध्मायजलजोत्तमं॥हर्षयन्विबुधानीकमा

रुरोहखगाधिपं॥२६॥इतिश्रीभागवतेमाहापुराणेअष्टमस्कंधेगजेंद्रमो

क्षणंनामचतुर्थोऽध्यायः ४ ॥शुभम्॥ ॥शुभम्॥ ॥

४८

॥गजें॥
॥१०॥

॥राम:॥
१०॥

आशा सफू कुथि
ASHA ARCHIVES
2969